DPN5460

Title : ~~श्रीकृष्णार्जुन सम्वादे~~ आदित्य हृदय स्तोत्र ĀDITYA HṚDAYA STOTRA

Run. No. 6151 Cat. No. 79 Micro. No.

Subject Hymn / स्तोत्र Religion : Hindu / Bauddha

Language : Skt. / New. / Nep. / Skt. - New. / Maith. - New. / New. - Nep. /

Size in cms. 20.5×9 Folios 1-14 13 Lines (in a page) 6

~~(1 page missing)~~ Seventh folio missing.

Compl. / Incompl. Chapt. / act /

Author / translator Scribe / donor

Date: NS / SS / VS / KS Ruler / place

Script : New. / Dev. / Bhuj. / Ran. / Illus. :

Material : palmleaf / paper / thyasaphu /

Condition : fine / damaged by worms, rats, water /

Beginning, colophon, post-colophon :

७८ ~~७८~~ आदित्यहृदय ७८

श्रीगणेशाय नमः ॐ श्रीसूर्याय नमः जवाकुसुमसंकासं काश्यपेयम्महाद्युतिं तमोऽरि
सर्वपापघ्नं प्रणमामि दिवाकरं अर्जुन उवाच ज्ञानं च धर्मशास्त्राणां गुह्याद्गुह्यतरं महत्
मया कृष्ण परिज्ञातं बाह्यं सचराचरं सूर्यस्तुतिमयं न्यासं वक्तुमर्हसि माधव भक्त्या दृष्टा
मि देवेश कथयस्व प्रसादतः सूर्यभक्तिं करिष्यामि कथं सूर्यप्रजयेत् तदहं कर्मविन्यासं
त्वत्प्रसादेन पांडव श्रीभगवानुवाच रुद्रादिदेवतैः सर्वैः पृष्टेन कथितं मया तदहं कर्म
विन्यासं शृणु यत्नेन पांडवं अस्माकं यत्त्वया पृष्टमेकचित्तो भवार्जुन तदहं संप्रवक्ष्यामि स्ना रामः १

दिमध्यावसानकं अर्जुन उवाच नारायण सुरश्रेष्ठ पृच्छामि त्वां महायशा कथमादि
त्यमुद्यन्तमुपतिष्ठेत्सनातनं श्रीभगवानुवाच साधु पार्थ महाबाहो बुद्धिमानसि पा
ण्डव यन्मां पृच्छस्युपस्थानं तत्पवित्रं विभावसोः सर्वमंगलमांगल्यं सर्वपापप्रणाश
नं सर्वरोगोपशमनमायुर्वर्द्धनमुत्तमं अमित्रदमनं पार्थ संग्रामे जयवर्द्धनम् वर्द्ध
नं धनपुत्राणां मादित्यहृदयं शृणु यत्कृत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः त्रिषु लोकेषु
विख्यातं निःश्रेयसकलं परं देवदेवं नमस्कृत्य प्रातरुत्थाय चार्जुन तस्मात्सर्वप्रयत्नेन स

आ॰ हृ॰
२

र्यमाराधयेत्सदा विद्यात्यनेकरूपाणि नश्यन्ति स्मरणादपि आदित्यहृदयं नित्यं जाप्यन्त
दृणपारग्व ॐ अस्य श्रीआदित्यहृदयस्तोत्रमंत्रस्य श्रीकृष्ण ऋषिः श्रीसूर्यनारायणो
देवता अनुष्टुप्छन्दः हरितहयरथं दिवाकरं घृणिरिति बीजं ॐ नमो भगवते जितवैश्वानर
जातवेदसे नमः इति शक्तिः ॐ नमो आदित्याय इति कीलकं मम सकलकामप्राप्त्यर्थं जपे वि
नियोगः ॐ अर्कमूर्ध्नि विन्यस्य ललाटे तु रविं न्यसेत् पद्मिन्यभोदं योश्चे वजिह्वानीक्ष्णा
करं न्यसेत् सुवर्णरेतसं कण्ठे स्कंधयोस्तीक्ष्णतेजसं बाह्वोस्तु पूषणं चैव मित्रं चैव तु पृष्ठ

राम: २

२

तः वरुणं दक्षिणे हस्ते त्वष्टारं वामतः करे हस्तावुष्णकरः पातु हृदयं तु गभस्तिमान् उदरं तु
यमं विद्यादादित्यं नाभिमण्डले कट्यां तु विन्यसेद्धंसं रुद्रमूर्वोस्तु विन्यसेत् जान्वोस्तु गोपतिं
न्यसेत्सवितारं तु जंघयोः पादयोस्तु विवस्वन्तं गुल्फयोश्च दिवाकरं बाह्यतस्तु तमोध्वंसं भगः
मभ्यन्तरे न्यसेत् सर्वाङ्गेषु सहस्रांशुं दिग्विदिक्षु भयं न्यसेत् एवमादित्यविन्यासो देवानाम
पि दुर्लभः इमं भक्त्या न्यसेत्पार्थ स याति परमां गतिं कामक्रोधकृतात्पापान्मुच्यते नात्र सं
शयः सर्पादपि भयं नैव संग्रामेषु पथिष्वपि रिपुसंघट्टकाले च तथा चोरसमागमे त्रिसं

आ॰हृ॰
२

ध्यं जपतो मासं महापातकनाशनं विस्फोटकसमुत्पन्नं तीव्रज्वरसमुद्भवं शिरोरोगं नेत्र:
रोगं सर्वव्याधिविनाशनं कुष्ठव्याधिस्तथा दद्रुरोगांश्च विविधास्तथा जपतस्तस्य नश्यन्ति म
माश्रृण तदर्जुन आदित्यमंत्रसंयुक्तमादित्यं भुवनेश्वरं आदित्यान्नापरो देव आदित्यः प
रमेश्वरं आदित्यान्नापरो देव आदित्यः परमेश्वरः आदित्यं सर्ववेदेषु आदित्य सर्ववेदि
वः यदादित्यमयं तेजो ममतेजस्तदर्जुन आदित्यः पश्यते येन तेन पश्यति भास्करः त्रिसंध्य
मर्च्चयन्सूर्यं मर्च्चयद्यः पठं नरं दारिद्र्यं नैव पश्यंति सप्तजन्मनु पार्थिवः त्रैगुण्येन तु त्रयो मंत्रा रामः २

त्रयो वेदास्त्रयोग्नयः उणवस्त्वं तुयः सूर्यास्तुरीयस्तु नमो नमः अजाय लोकत्रयभावनाय
सर्वात्मने गोपतये वृषाय सूर्याय सर्गप्रलयोद्भवाय नमो महाकारुणिकोत्तमाय एतन्ने क
थितं पार्थ ह्यादित्यहृदयं मया यच्छ्रुत्वा मुच्यते पापैः सूर्यलोके स राजति आदित्यः सविता सू
र्यः खगः पूषा गभस्तिमान् सुवर्णस्फटिको नु स्फुरनो विश्वतापनः हिरण्यगर्भस्त्रिशिराः स
र्वदो भास्करो रविः मार्त्तण्डो गोपतिः श्रीमान् कृतज्ञश्च प्रतापवान् हिरण्यगर्भस्त्रिशिराः स
र्वदो भास्करो रविः नमिश्रलाभगो हंसो नासत्यश्च नमोनुदः शुद्धो विरोचनः केशी सहस्रांशु

श्री सू
५

र्महाप्रभुः विश्वात्मा स्रष्टा लोकानां सुमितिहिरोनित्रलापकान् धर्मरश्मिपतंगव दारंलोमित्रमा
तपः हरिर्वित्तेयगतिः भूरस्तेजोराशिर्महायशाः शंभुस्त्रिवांगदोषो प्योत्स्वप्रकप्रभुदायक
अंशुमानुत्तमोदेवो ऋग्यजुःसामसंभव हरिदश्वः कर्मसाक्षी सप्तसप्तिर्मरीचिमान् अ
ग्निर्दितेपुत्रः शंभुस्तिमिरनाशनः पूषा विश्वंभरो मित्रः सुवर्णः सुदीपकः आतापी
मण्डलो भानुस्तापनो विश्वतापनः कविर्विश्वो महातेजाः सर्वरत्नमयोद्भवः अक्षरश्चा
क्षरश्चैव प्रभाकर दिवाकरो वह्निर्वाग्दः लोमहस्त्रकवयफलप्रदः अंगारकोऽपदाः रामः
४

सोमस्याऽश्चांगवर्द्धनः बुधोबुद्धासनोबुद्धिबुद्ध्यात्मा बुद्धिवर्द्धनः बृहद्भानुर्बृहद्भासो बृहद्धामा
बृहस्पतिः शुक्रः शुक्रकरो नाथ्यः शुक्लांगः शुक्लभूषणाः शनिमान् शनिरूपस्तु शनिर्गतिः सर्व
दा अनादिरादिरूपंस्तु आदित्योदिग्पतिर्नमः आनुमान्भानुरूपस्तु स्वर्भानुर्दीप्तिमान्
धूमकेतुर्महाकेतुः सर्वकेतुरनुत्तमः तिमिरांगादनः शंभुस्त्वष्टा मार्त्तण्ड एवच नमः पू
र्वाय गिरये दक्षिणाय नमोनमः नथापरायगिरयेऽत्तराय नमोनमः नमपमप्रबोधा
य नमस्ते द्वादशात्मने नमोनमः सहस्रांशो आदित्याय नमोनमः नमोविश्वप्रबोधाय नमो

श्री·ह·
५

ग्नात्रिस्तु विश्वात्मे ज्योतिषञ्च नमस्तुभ्यं ज्ञानार्काय नमो नमः प्रदीप्ताय प्रगल्भाय युगान्ता
य नमो नमः नमोङ्कार वषट्कार सर्वयज्ञ नमो नमः ऋग्वेदादि यजुर्वेद सामवेद नमोस्तु
ते नमो हाटकवर्णाय भास्कराय नमोस्तु ते जयाय जयरूपाय हरिदश्वाय ते नमः दिवा
य दिव्यरूपाय ग्रहाणांपतये नमः नमस्ते लोकनाथाय भूतानांपतये नमः नमस्तेस्तु
वयनित्यं सर्वकृत्कृतात्मने नमो वैकल्पनाशाय नमस्ते जगदात्मने त्वं ज्योतिस्त्वं द्युतिर्ब्र
ह्मा त्वं प्रजास्त्वं प्रजापतिः त्वमेव रुद्रो रुद्रात्मा वायुरग्निस्त्वमेव हि योजनानां सहस्रे द्वे द्वे शते

रा·म·
५

द्वे च योजने एकेन निमिषार्द्धेन क्रममान नमोस्तु ते अग्रतश्च नमस्तुभ्यं पृष्ठतश्च नमो न
मः पार्श्वतश्च नमस्तुभ्यं नमस्ते चास्तु सर्वतः नमः सुरारिनाशाय सोमसूर्याग्निचक्षुषे
नमो वेदाय शोभाय सर्वमंत्रमयाय च अरुणो माघमासे तु सूर्यो वै फाल्गुने तथा चैत्रमासे
तु वेदाङ्गो भानुर्वैशाखतापनः ज्येष्ठमासे तपेदिन्द्र आषाढे तपते रविः गभस्तिः श्रावणे मा
सि यमो भाद्रपदे तथा हिरण्यरेता चाश्विन्यां कार्त्तिके च दिवाकरः मित्रो मार्गशिरे मासे पौ
षे विष्णुः सनातनः पुरुषोत्तमोधिके मासे मासानां परिकीर्त्यते इत्येते द्वादशादित्याः का

श्री·सू·
६

धेयाप्रकीर्त्तिताः उग्ररूपा महात्मानस्तपने विश्वरूपिणः धर्मार्थकाममोक्षाणाममवश्यं
हेतवो नृपः सर्वपापहरश्चैव आदित्यः प्रकृअभेत एकधा दशधा चैव शतधा च स
हस्रधाः तपन्ति विश्वरूपेण संहरन्ति सृजन्ति च एष विष्णुः शिवश्चैव ब्रह्मा चैव प्रजापति
महेश्वरो महेन्द्रश्च यमो वरुण एव च नक्षत्रग्रहताराणामधिपो विश्वभावनः वायुर
ग्निर्धनाध्यक्षो भूतकर्त्ता स्वयंप्रभुः एष देवो हि देवानां संहर्त्ता रक्षकस्तथा एष लोकानुः राम:
कानुकारश्च सप्तद्वीपाश्च सागराः एष पाताललोकाश्च दैत्यदानवराक्षसाः एष धातावि ६

ते पार्थ एकाग्रकृतमानसः सुवर्णचक्षुर्भवति न चाधस्तु प्रजायते पुत्रवान्धनसंपन्नो जा
यते निरुजः सदा आदित्यहृदयं पुण्यं सूर्यनामविभूषितं श्रुत्वा च निखिलं पार्थ सर्वपापै
ः प्रमुच्यते अतः परतरं नास्ति सिद्धिकामस्य पाण्डव एतज्जपपरः कौन्तेय येन श्रेयो ह्यवाप्स्य
सि आदित्यहृदयं पुण्यं यः पठेत्सुसमाहितः भ्रूणहा मुच्यते पापात्कृतघ्नो गोघ्न एव च यद्
दंष्ट्राणां यानि त्वं जपेद्वापि समाहितः सर्वपापविमुक्तात्मा सूर्यलोके महीयते अपुत्रो लभ
ते पुत्रान्कुजन्माजन्मनामाप्नुयात् कुरोगी मुच्यते रोगाद्भक्त्या यः पठते सदा यस्त्वादित्यदिने:

ग्र·ह·
८

पार्थमाभिमात्रोदकेस्थितः उदयाचलमारूढं भास्करं प्रणतः स्थितः जपन्नेमान्त्राभक्त्या
श्रृणु पार्थापि भक्तितः यथातिपरमं स्थानं यत्र देवो दिवाकरः अमित्रदमनीं पीडां यदा कर्त्तुं
समाचरेत्तेन तदाप्रतिकृतिं कुर्याद्धतेऽर्श्वरणपांशुना आक्रम्य वामपादेन आदित्यहृद
यं जपेत् ॐ हिमालि स्वाहा ॐ हिमालीदं स्वाहा ॐ तिलीट स्वाहा त्रिभीरुरोगी भवति
ज्वरी भवति पंचभिः जपैस्तु सप्तभिः पार्थ राक्षसस्तनुमाविशेत् राक्षसेनाभिभूतस्य विकाः राम:
रा दृश्यपार्थ गायतेनृत्यतेनग्न आस्फोटयेत्तिधावति शिवाहृतं प्रकुरुते क्रन्दते च पुनः ८

पुनः एवं संपीड्यते पार्थ यद्यपि स्यान्महेश्वरः किं पुनर्मानुषः कश्चिद्दोषाचारविवर्जितः
पीडितस्य च संदेहो ज्वरो भवति दारुणः यदा चानुग्रहं तस्य कर्त्तुमिच्छेद्द्युभंकरं तदा सलिलैः
मात्वाय जपेन्मंत्रं मताबुधः ॐ नमो भगवते तस्मै आदित्याय नमो नमः जपाक्षजयभद्रायः
तरिद श्राय तेनमः स्नापयेत्तेन मंत्रेण शुभं भवति नान्यथा म[illegible]याचमवेदाखोनरपते
नात्र संशयः सर्वमेनिखिलः डोकः हमांचैव निवोधमे उपलिप्य शुचौ देशे नियतो वाग्यतः
शुचिः हनंवाचचतुरस्रं वा मण्डलं गोमयेन तु अष्टपत्रं लिखेत्पद्मं लिप्तं गोमयमण्डले

श्रीः
१

पूर्वपत्रे लिखेत् सूर्यं मानेयातु रविं न्यसेत् याम्यायैव विवस्वन्तं त्रैनैऋत्यां च भगं न्यसेत्
वारुणो वरुणं विद्यात् वायव्यां मित्रमेव च आदित्यमुत्तरे पत्रे ईशान्यां विष्णुमेव च मध्ये तु भास्क
रं विद्यात् क्रमेणैव तन्मर्चयेत् अनुष्ठानं भवत्येवं क्रमेणैव समर्चयेत् अतः परं प्रवक्ष्यामि
ब्रह्मिकामस्य भारत महातेजसमुद्यन्तं प्रणमेत् कृताञ्जलि सकेशराणि पद्मानि करवीराणि
पाण्डवः तिलतण्डुलसंयुक्तं कुशांघोदकेन तु रक्तचन्दनमिश्राणि कृत्वा वै ताम्रभाजने हत्वा राम:
शिरसि स्थाप्य जानुभ्यां धरणीगतः मंत्रपूतं गुडाकेशं दद्यादर्घं भगस्तिने ॐ विद्याहरिः १

कुरु कष्टे सर्वार्थसाधनी स्वाहा ॐ ह्रां ह्रीं ह्रूं सः सूर्याय स्वाहा ॐ नमोस्तु सूर्याय सहस्ररश्म
ये· नमोस्तु वैश्वानर जातवेदसे त्वमेव चार्घ्यं प्रतिगृह्ण देवाधिदेवाय नमो नमस्ते नमो भग
वते तुभ्यं नमस्ते जातवेदसे दत्तमर्घ्यं मया भानो त्वं गृहाण नमोस्तु ते एहि सूर्य सहस्रांशो तेजो
राशे जगत्पते अनुकम्पाय मां भक्त्या गृहाणार्घं नमोस्तु ते ॐ नमो भगवते सूर्याय नमः आ
दित्याय नमः श्रियाय नमः आदित्यस्य शिवं विद्यात् शिवमादित्यरूपिणं उभयोरन्तरं नास्ति
आदित्यस्य शिवस्य च एतद्विद्या महं कर्तुं प्रकृषो वै दिवाकरः पत्र व्यालान बाधन्ते व्याधि भ्योने

आ·हृ· १० भयं कवित् उदये ब्रह्मरूपस्तु मध्याह्ने तु महेश्वरः अस्तमाने स्वयं विष्णुस्त्रयीरूपी दिवाक
रः नमो भगवते तुभ्यं वैष्णवे जातवेदसे मामार्घ्यं प्रतिगृह्न त्वं देवदेव नमोस्तुते हिमघ्नाय त
मोघ्नाय नमो नमः अक्रूरघ्नाय देवाय नक्षत्रसूर्यात्मने नमः हरितहयरथं दिवाकरं तं क
नकमयाम्बुजरेणुपिञ्जलं प्रतिदिनमुदये नवं नवं शरणमुपैमि हिरण्यरेतसं जयो ज
यश्च विजयो जितप्राणो जितश्रमः नमो जयो जितक्रोधो वाजितः सप्तकीर्तिताः न तत्र
व्यालावाधने व्याधिर्भयं चैव भयं न च न नागेभ्यो भयं चैव न च भूत भयं क्वचित् अग्निशत्रुभ रामः १०

यत्रास्मि पार्थिवे भस्तथैव च दुर्गतिं न रते घोरां प्रजांश्च लभते पशून् सिद्धिकामो
लभेत्सिद्धिः कन्याकामस्तु कन्यकाः एतत्पठति कौन्तेय भक्तियुक्तेन चेतसा अश्वमेधस
हस्रस्य वाजपेयशतानि च कन्याकोटिसहस्रस्य दत्तस्य फलमाप्नुयात् इदमादित्यहृ
दयं योधीते सततं नरः सर्वपापविशुद्धात्मा सूर्यलोके महीयते नास्त्यादित्यसमो देवो
नास्त्यादित्यसमो गतिः प्रत्यक्षो भगवान् विष्णुर्यत्र विविष्णु प्रतिष्ठितं गवां शतसह
स्रस्य दत्तेन यत्फलं तत्फलं लभते नित्यं शत्रुनाशनमौनि यो रविं यो धीते सूर्यहृदयं

श्री.सू.
११

सकलं सुफलं भवेत् श्रद्धानां ब्राह्मणानां वलि लिखित्वा वसमर्पयेत् ब्रह्मलोके ऋषिणां
वयत्र वा मानुषेष्वति जायते मानुषे वापि जातिस्मरणमाप्नुयात् श्रीजायलोकत्रयः
पावनाय सर्वात्मने गोपतये हषाया सूर्याय सर्वप्रलयान्तकाय नमो महाकारुणिको
त्तमाय विवस्वते ज्ञानभूतान्तरात्मने जगत्प्रदीपाय जगद्धितैषिणे स्वयंभुवे दीप्त
सहस्रचक्षुषे सुरोत्तमायामिततेजसे नमः सुरैरनेकैः परिसेविताय हिरण्यगर्भा
यहिरण्मयाय महात्मने मोक्षदाय नित्यं नमोस्तु ते वामरकारणाय आदित्यस्त्वः रामः
११

र्चितो देवैरादित्यः परमं पदं आदित्यो मातृकामूर्त्यावादित्यो वाप्ययं जगत् आदित्यं पश्य
ते भक्त्या संतोषयति मानवः ब्रह्मा विष्णुश्च रुद्रश्च तुरीयं च नमोस्तु ते नमः सवित्रे जगः
देकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मधारिणे विरिंचिनारा
यणशंकरात्मने यसोदयनेत जगत्प्रबुध्यते प्रवर्त्तते चाखिललोककर्म्मसिद्धये ब्रह्मेन्द्रनारा
यणरुद्रवन्दिते नतः सदापद्मतु मंगलं रविं नमोस्तु सूर्याय सहस्ररश्मये सहस्रशा
खान्वितसंभवात्मने सहस्रयोगोद्भवभावभाजिने सहस्रसंख्यायुगधारिणे नमः सप्त

श्री·ह· १२ ण्डलं दीप्तिकरं विशालं· रत्नप्रभं तीव्रमनादिरूपं दारिद्यःदुःखक्षयकारणं च· पुना
तु मां तत्सवितुर्वरेण्यं यन्मण्डलं देवगणैः सुपूजितं· विप्रस्तुतिर्भावनमुक्तिकोविदं
तं देवदेवं प्रणमामि सूर्यं· पुनातु० यन्मण्डलं ज्ञानमयं वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्म
रूपं समस्ततेजोमयदिव्यरूपिणं· पुनातु० यन्मण्डलं व्याधिविनाशदक्षं· यदृग्यजुः
सामसु संप्रगीतं प्रकाशितं येन च भूर्भुवः स्वः पुनातु० यन्मण्डलं वेदविदो वदन्ति रामः
मर्त्यमर्त्यासुरसिद्धयक्षाः यद्योगिनो योगजुषां विसंघाः· पुनातु० यन्मण्डलं सर्वजनेषु पू १२

जितं· ज्योतिश्च कुर्यादिह मर्त्यलोके यत्कालकालादिमनादिरूपं· पुनातु० यन्मण्डलं
विष्णुचतुर्मुखाख्यं यदक्षरं पापविहरदक्षं यत्कल्पक्षयकारणं च· पुनातु० यन्मण्डलं
विश्वसृजां प्रसिद्धं· मुत्पत्तिरक्षाप्रलयप्रसिद्धं यस्मिन् जगत्संहरतेखिलं च· पुनातु
० यन्मण्डलं गतस्य विष्णो· रात्मा परं धाम विशुद्धतत्वं सूक्ष्मान्तकैर्योगरतैः प्रसिद्धं· पु
नातु० यन्मण्डलं वेदविदो वदन्ति· गायन्ति यच्चारणसिद्धसंघाः यन्मण्ड त्रिणो मन्त्रवि
दः स्मरन्ति· पुनातु० यन्मण्डलं ब्रह्मविदोपगीतं· यद्योगिनां योगपथानुगम्यं तं सर्व

श्री॰ ह॰ देवं प्रणमामि सर्वदा॰ श्रुत्वा तु मोनन्तस्सवितुर्वरेण्यं मण्डलाख्यं वदिदं पुण्यं यः पठेत्सतत
१२ नरः सर्वपापविशुद्धात्मा सूर्यलोके महीयते ध्येयः सदा सवितृमण्डलमध्यवर्ती॰ नाराय
णः सरसिजासनसन्निविष्टः केयूरवान् मकरकुण्डलवान्किरीटी॰ हारि हिरण्मयवपुर्धृत
शंखचक्रः सशंखचक्रं रविमण्डलेस्थितं कुशेशयाक्रान्तमनन्तमच्युतं भजामि बुद्ध्या तपनी
यरूपिणं सुरोत्तमं चित्रविभूषणोज्वलं वेदवेदांगशरीरं दिव्यदीप्तिकरं परं रक्षोघ्नं रक्तवर्णं
च सृष्टिसंहारकारकं लोकप्रभाकरश्चैव लोकचक्षु महेश्वरः तपनस्तापनश्चैव शुचिः सप्ताश्ववा रा॰ म॰
हनः एकचक्ररथो यस्य दिव्यकनकभूषितं सोमे भवतु सुप्रीतः पद्महस्तो दिवाकरः आदित्यं १२

प्रथमं नाम द्वितीयं तु दिवाकनकभूषितं सोमे भवतु सुप्रीतः पद्महस्तो दिवाकर॰ आदित्यं प्रथ
मं नाम द्वितीयं तु दिवाकरं तृतीयं भास्करं प्रोक्तं चतुर्थं तु प्रभाकरं पंचमं तु सहस्रांशुं षष्टं
त्रैलोक्यलोचनं सप्तमं हरिदश्वं च अष्टमं च अहः पतिं नवमं दिनकरः प्रोक्तं दशमं सूर्यमे
व च एकादशं त्रिमूर्तिश्च द्वादशं द्वादशात्मकं द्वादशैतानि नामानि प्रातःकाले च यः पठेत् दुःस्व
प्ननाशनं सद्यः सर्वदुःखं च नश्यति दद्रुकुष्ठहरं चैव सर्वकामप्रवर्द्धनं यः पठेत्प्रातरेवाह्निसन्ध्या
नित्यमिदं नरः सौख्यमायुस्तथारोग्यं लभते मोक्षमेव च अग्निमीडे नमस्तुभ्यं इषेत्वोर्जे स्वरूपिणे
अग्निमायाहि वीतस्त्वं नमस्ते ज्योतिषां पते शन्नोदेवी नमस्तुभ्यं जगच्चक्षुर्नमोस्तु ते पञ्चमाय नः प

श्री हृ.
१४

पद्मकरः पद्मगर्भसमद्युतिः सप्ताश्वरथसंस्थश्च द्विभुजः स्यात्सदा रविः आदित्यस्य नमः
स्कारं ये कुर्वन्ति दिने दिने जन्मान्तरसहस्रेषु दारिद्र्यं नैव जायते नमो धर्मविधानाय नमस्ते
कृतसाक्षिणे नमः प्रत्यक्षदेवाय भास्कराय नमोस्तुते उदयगिरिमुपेतं भास्करं पद्मह
सकलभुवननेत्रं रत्नरत्नोपधेयं तिमिरकरिमृगेन्द्रं बोधकं पद्मिनीनां सुरवरमभि
वन्द्य सुन्दरं विश्वदीपं इति श्रीभविष्यपुराणे श्रीकृष्णार्जुनसंवादे आदित्यहृद
यस्तोत्रं सम्पूर्णसमाप्तशुभम ॥

राम:
१४